॥श्री॥

शतचंडिविधानं ॥ रुद्रयामले ॥ शतचण्डीविधानञ्च
प्रोच्यमानं मया श्रृणु ॥ सर्वोपद्रवनाशाय शतचं-
ण्डी समारभेत् ॥ षोडशस्तंभसंयुक्तं मण्डपं प्र-
कल्पयेत् ॥ वस्त्रको [illegible] तान् वेदीमध्ये कुर्यात् त्रिभाग
तः ॥ पञ्चवर्णकचितारम्याम् धूप[illegible] समाचरेत् ॥
पञ्चवर्णरजोभिश्च कुर्यान्मण्डलकं शुभं ॥ पंच
वर्णवितानञ्च किंकिणीजालमण्डितं ॥ आचा-
र्येण समं विप्रान्वरये दश सुव्रतान् ॥
ईशान्यां स्थापयेत्कुम्भं पूर्वोक्तविधिना हरे ॥ वारुण्याञ्च
प्रकर्तव्यं कुण्डं लक्षणलक्षितं ॥ प्रतिदिव्याः प्रकर्तव्याः
सुवर्णस्य पल्लेन वै ॥ तदर्द्धेन तदर्द्धेन देवे
सुवर्णस्य पल्लेन वै ॥ तदर्द्धेन तदर्द्धेन देवेश
मानमते ॥ आचार्यः दशमानान्देवीं कुर्याद्वा दशकरामा
पापि ॥ पद्मकुले प्रगृह्णानां वेदिमध्ये निधापयेत्
देवीं संपूज्य विधिवज्जपं कुर्युर्दशद्विजाः ॥ शतमा
[illegible] नवार्णेन ॥ चण्डीसप्तशती
मध्ये सम्पूज्य प्रत्येकं सहितं ॥ एकैकं [illegible] ॥
पाठेन चतुर्थे ॥ कृपा [illegible] प्रजा [illegible]
कर्मा [illegible] चरेत् ॥ पंचमे दिवसे प्रातर्[illegible]
द्रव्या [illegible] गुडूचीपायसं [illegible] तिलान् [illegible]
नपि ॥ चण्डीपाठस्य होमं तु प्रति[illegible]
पतनं ॥ होमं कुर्याद्दि [illegible] सपा [illegible]
न्[illegible] मान ॥ [illegible] दद्याद्द्विजे
भ्यो दक्षिणां [illegible] ॥ कपिलां गां [illegible]
[illegible] ॥
[illegible] कं [illegible] मानस्य [illegible]
जः ॥ एवं कृते महेशानि [illegible] प्रदा
यकः ॥ इति शतचण्डीविधानं ॥

H-34 धर्मरत्न बज्राचार्य सुरत श्री महाविहार

सहस्त्रबलिकापाठोयं क्रयाह्वाकारयनते ।।
आपकालसुशान्तप्रीताबषद्रुस्त श्रामंए
पा ।।१।।